DPN 5320

Title : पुष्पमालास्तव PUṢPA MĀLĀSTAVA

Run. No. 6011 Cat. No. 303 Micro. No.

Subject Hymn स्तव Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 9 × 17'5 Folios 4 (54, 56, 57 & 59) Lines (in a page) 8

Compl. / Incompl. Chapt. / act / verses 3 – 7, 13 - 22, 29 – 33

Author / translator Scribe / donor

Date: NS / SS / VS / KS 897 Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water / folio missing.

Beginning, colophon, post-colophon :

इति गिरिप(ु)त्रीपाद(र)राजीवनुधा, नवनममलयन्ती कीर्त्तिसौरभ्य पूरे ।
सरभल मकरंदस्यान्दिनीमाम्निबद्धामदयाति कवेन्द्र:मातृका पुष्पमाला ॥३३॥
इति पुष्पमाला स्तव सम्पूर्ण ॥ ॥सं ८९७ चैत्रशुदि ११ शुक्रवारे संपूर्ण ॥ ॥

३०३ पुष्पमालास्तोत्र

नीकदे. गणाधीशितनरत्नकुण्डलरुचे गंगाधरालिंगिते। गातद्
र्थे गजसुन्दरीसमगते गं अर्द्धनार्द्धिते, गांगे अस्थसविद्विषांगम
ध्ये गंगाप्रवाहाकृपार॥३॥ गीते गीतिविवक्षणे गिरिसुते गी
र्वाणवाणिप्रदे गेहीभूतसमस्तभूतहृदये गीर्व्वाणगीर्भिस्तु
ते। गुह्याधारगते गुणारिणि गुदे गुह्याग्रमाचारदे गुप्ते गौ
रि गुरुप्रसादसुलभे ग गुर्वर्थमीक्षस्व मां। घंटाहेघंटिकाक
लाकटिलवाकारे घवाधारिके घ●णाघर्घरिका घटाघ
नघनाघोरादिसप्रत्यये। घर्मज्योतिरघर्धिरश्मिविदितेघ

पु॰म॰ ध्यानिन्तके मेघच्छते, धाराधरैटरते घनान्धटयमे घोरान घोरेघ
५८ एीम्। वारूढ्बार गते दशावरजगन्मान ध्वतुर्वर्गदे, वार्द्धकादिपु
गात्त पावकशिखे वा मुठिके वाशिउके। वक्षुस्येचतुरे चतुर्द्धि अ
वबोवस्येचतु र्आत्मिके ॥ चक्रस्थे ममवर्द्धनाम्निलरविते वर्य्ये वह
शान्तः सदा ॥ ६॥ हृदोगकारकौमुदि हृविमतिः स्वहृदतामालिः
नि, हृध्याद्रेके हृलिनि हृलोक्षितमुदेयहिन्नसंभावने। हृन्ने संसर
तामनस्वयनिमां, हृन्नेतरे बुद्धिषु, हायेविदुरताद्धलं कृतिमन
न स्वहृदमन्हासये ॥७॥ जन्मस्थेजननादिहीनपुरुजिज्ञायेन

राम
५८

मार

स्वरितेनरवेनवीनेतरे, नामस्तोत्रपविविरतृतनय नानाविधानिःकृते
। नवेवानशिरोनदीशशिकलाः नागार्च्चितां घ्रिद्वये, नादोनदयत्नगे
मुनन येनाथानु नानाकृते ॥८॥ निर्मासेनिरवग्रहे निरवधेनिराकार
ऐ निरकले, निःसंगेनिरुपाधिकेनिरूपमेनिर्द्विक्रियेनिद्व्ये ॥ नि
ध्यन्ने निराधे नितत्तरपदे निर्वासनेनिर्मिते ॥९॥ निर्देधातुन वेनि
रत्तरपदे नित्यंनिरीक्षस्वमान ॥१०॥ पातालोर्द्ध गते परापरमते प
श्यंयनामाश्रिते, पत्थापूजितपादुके परकलेपश्चासने पार्वती ॥
पशोप [illegible] जन्मरहविनवे परयाक्षिपश्चासने, पारावृदेदिनि

पु॰न॰पारदायिनि परम्पारं परदे हि मे ॥५॥ पूज्ये पूज्यतरे परस्पर मते पू
५८ ज्यस्तुकावस्थिते. पूर्णे पूर्ण गिरि प्रदेश ललिते पूज्यो पहारप्रिये ॥
पारम्पर्य परस्परापरिचिते पुण्ये कगम्ये परे. पूर्वाम्नाय गते पुरन्दर
नुते पश्चानने पश्य मां ॥६॥ वन्दे बुध पुराङ्ग शक्ति जननि ब्रह्मादि
लास्त्र प्रिये. वानानामक्षि देवते रतिपते वालेन्दु चूलास्पदे। वीन्नत्सो
स्पद चिन्मल त्रिपथगे विद्युत्प्रभावावृते. बुद्धीनामुपरि स्थिते तनु राम
न्द्रतां बुद्धे नमस्ते सदा ॥७॥ भासे वेभसि न्नास्तुते दिनमणौ नागीरथि ५८
कम्यातले. भक्तेणी गगनेन्लवह्नि हुरगे भर्गाङ्गमाउग्रे वरे। भस्माकार

ग्व
विद ग्वं के कुनवदेन्नालंकृते मन्मथे. ना कैवल्लिजने न्नवानि नुवने न
त्तुप्रियं देहि मे ॥८॥ मद्दष्टे मदनिष्ठकल्पलतिके मत्संयते मद्धते
मत्सिद्धे मविनिष्ठते मदधिपे मद्भावने मद्धते। मद्विद्धे मदशेषवंधु
जमने मद्वेतने मन्मथे मन्यातः मदनुग्रहं कुरु शिवे मज्ञानि मद्देवते।
मीमांसा धृमिते नतेरतिपते मीन ध्वजाहंकृते मिथ्याज्ञानदवाग्नि मे
घक सुधा मेघावली विभ्रमे। मध्ये नागमदे [illegible] दिते मुनिजन स्वा
ते श्च स्वर्ग्ये मुकुः मूला आर मुखोद्गते राशि मुखे मुग्धे मुखं देहि मे।
।२०॥ यष्टव्ये यजमानरूपिणि यमाद्यष्टाङ्गयोगात्मिके यातरोज

६५

पु.स्त. गकृंगते यमनटेकुन्नंगनीमोदये। यज्ञाधारगते यशस्विनि
५० यमेयोगेश्वरराजिते. यक्षेशप्रियवल्लभे यमधने यज्ञेतुरगक्क्रः
स्वमां ॥२१॥ रम्येरम्यतरेतिरक्तांशाकलेरक्तांशुकैरंजिते. रागद्वे
षविहीनवित्तसुलग्नेरक्तोरुरक्ताधरे। रक्तेसस्वरजस्तमोवलिः
शिखिज्वालेरस्यागमे रक्ताचन्दुनिन्नाननेरतिपातिद्वेविप्रिये
रक्षमां॥२२॥ लक्ष्मीवन्द्यपदेलयोद्भरकथाहीनेलतासन्निभे
लावण्यप्रकृतेलसन्मृणालगतेलाक्षाद्रपादाम्बुजे। लक्ष्याधारमं राम
नोगतेललितदेलब्धक्रमाराधिने. लज्जासालिनिलाकिनित्रि ५०

केचरिब्रह्मलान्तरगते ब्रह्मोणामध्यास्थिते ब्रोदालंकृतविग्रहे ब
हुगुणेब्रह्मिशनालीस्थिते। ब्रह्मोणेश्वरि ब्रह्मवासनिशिवेब्रह्मातुः
सारप्रिये. ब्रह्मीसासैनिब्रह्मन्वयेशिरवटिकेमांपाहिब्रह्मोभि नि॥
२९॥ साध्येसिद्धसरस्वतीधृतिमयेसिद्धान्तसिद्धेश्वरि. सिद्धेरां
रिविनिसारदे[illegible]तिकरि श्रीकण्ठनाथार्चिते। सिद्धस्थेसमपेशुभां
शुवहणेसिद्धावलीसेविते. सिद्धान्तादिनवासन समुदिते साङ्केसुटः
सिद्धान्तव॥ ३०॥ ह्रींकारस्वरसंन्नदे हरिणतेहरामत्तरे. हंसस्थे
हरदेवतेहितकरे हेमाम्बुजानेहरे। हेरम्बेहरितान्बरे हयगते ह्रीं

रक्षि

पु.म. सोपहारे हरे. ॐकाराय कृता सुरेन्द्रमणिक चे हंसि प्रसीद त्वम॥
५९ ३१॥ क्षय प्रक्षय पदे कलक्षणाविभि क्षोदप्रमाणि क्षणि क्षिप्राद
क्षिणाकुक्षिरि क्षित मनः क्षत्रज्ञ संरक्षणि। क्षत्राधीश समर्द्धिते ॐ
क्षिति हरे क्षेमप्रदे स्तुत्रिये. क्षत्र यं क्षितिन्द्रसुते नुतिवचः क्षुद्रं
मदे दंत्वया॥३२॥ इति गिरिवरपुत्रीपाद राजीवभूषा. नवनमम
लयन्ती कीर्त्ति सौरभ्यपूरे। सरसमकरंद स्यन्दिनी मन्निवद्धा
मदयति कविन्द्र भ्रामातृकापुष्पमाला॥३३॥ ॥इति पुष्पमा राम
लास्तव सम्पूर्णं॥ ॥सं ८९७ चैत्रसुदि॥शुक्रवारे संपूर्णं॥ ॥ ५९